आशा सफू कुथि
ASHA ARCHIVES
1.209

संस्मार्कं बुद्धाय ॥ गद्य था ॥ ॐ पूर्ण्यरमसायूर्ण्यप्रयतिमित: स्ना
नसंतानायाविन ॥ ॐ सर्व्वसंस्कारनयाने द्ध: धर्म्मि ग: नग्नल
समृङ्ग: ण्यलावविशुद्ध:मसानयपतिवानस्वाहा ॥ ८ ॥
नेनस्वस्तुपुनश्च समयन: वज्रि गनीनां: बुद्धकाटीनां: मकुमगने
कुस्वनग ॥ हृदमयतिम्भिनायूसुकलाविर्मा ॥ नंचेथा ॥ ॐ पूर्ण्य

ॐ नमो भगवतः जयत्रिमित्राय् ज्ञानसत्वनिर्म्मितः मजात

जाय: तथागतायां इक्षसम्यक्संबुद्धाय॥ ॐ पूर्ण्य रम सायूंम्य:

श्रे जयत्रिमित्राय् ह्रीं पूंर्य ज्ञानसत्ता नायचित॥ ॐ सर्व्वसत्तानय ६

निशुद्धः धर्म्मितः गगनसमुत्पन्नः स्वभावविशुद्धः महानययति

वासत्वाहा४॥ ह ॥ तनरवत्पूनक्षसमयतनाबद्धिं गमीनीःवू

द्ध काठीनोमकमतः नेसतनतः ह्र दं मयत्रिमित्राय भसूवली

क्षित॥ ॐ नमो भगवते जयत्रिमित्राय् ज्ञानसत्विकितः मजात

जाय: तथागतायां इक्षसंम्यक्संबुद्धाय॥ तयथा॥ पूंण्यरमहापू

ण्यजयत्रिमितः पूंन्य ज्ञानसत्ता नायचित॥ ॐ सर्व्वसत्तानय:

निशुद्ध धर्म्मितः गगनसमुत्पन्नः स्वभावविशुद्धः महानय

यतिवात्रसाहा ॥ १० ॥ गननखतूपूनश्ससमयनश्यंचबृविं:
गतिनां: वृद्धकाढिनी: मकमर्गनेस्वनेन: छंदमुयतिमिगायु
श्रीः ष्ठसूत्रंताविन ॥ ॐ नमोरगवनः अयतिमिगायुज्ञानसुविनि १०
श्चितनजोनाजायन थागनाया: ईकसमा सक्वृद्धीयन ॥ तयथा ॥
यूंच्यरमरतायूंन्यअयतिमितः यूंन्यज्ञानसंतानाचितन ॐ सर्व:

सस्कासयनीशुद्धः धर्मतः गगनसमुद्गता स्वभावविशुद्ध महा
नयपतित्रसाहा ॥ ११ ॥ गननखतूपूनश्ससमयन्नश्दमगगान:
दीवासूकायमोनें: वृद्धकादीनां: मकमगनेस्वनन: छंदमयति
मितायुसूत: ताविन ॥ ॐ नमोरगवन: अयतिमितायुज्ञानसुवि
निश्चितः नजोनाजायन थागनाया: ईकसम्यक्संवृद्धीय ॥ तद्यः

थ॥ युंध्य र महा युंध्य ऋयति मिनयुंध्य ह्लान सहा नायकिन ॥ ॐ
सर्व्वसस्कान्सयति शुद्धः धर्म्मिनः गगनसमज्ञनः स्वहा वविशुद्धः
श्री महानयः यनिनस्वाहा ॥ १२ ॥ ॐ दमयति मिनायु ४ सत्पुः तिख्वि ११
ख्यकिः सिखायथि ख्यकिः सगनायुथावर्थभनायुथालवकि ॥ ॐ
नमोलग नः ऋयमिनायु ह्लान सविनि ख्विनः नजीनाथयन

थगनायां स्कसम्य स्कसवुध्वाः नयथाँ ॥ ॐ युंध्य र महा युंध्य ऋयति
मिनयुंध्यः ह्लान सहा नायकिनः ॐ सर्व्वसस्कान पनि शुद्धः धर्म्मिनः
गगनसमज्ञनः स्वाहा दविशुद्ध महानयपनि वानस्वाहा ४ ॥ १३
य ४ ॐ दंजयति मिनायु ४ सत् ॐ सिखिख्यकिः सिखायथि ख्यकि थाः
सनकदाचित्तनकथूयय यम ॥ कीर्यांज्य नीनयमसीकः नः
चरुनायय लोनकदावि: दयि पुनियँत स्पय न ॥ यप यजेउ स्म

न्यूपयय्यक्र॥गत्रगत्र:जानीजानी स्मनारवि॥ॐ नमा रगवन
त्र्यतिमिमायूह्लानसूविनिम्चित:गजानाजाय:गथागगायार्द
श्रे कस्तव्वूर्द्वाय॥गयथा॥पूंज्यरमसापूंब्यत्र्यतिमिपूंज्यस्ला: १३ १४
१२ नसंतानाविन॥ॐ सर्व्वसस्वनयतिशुर्द्द:धर्म्मगा:गगगसमू
भस्वतावविशुर्द्दमसानयपतिवानसातास॥ १४॥ यः ॐ द

त्र्यतिमिनायू॥ सूर्पलिखिष्यति:लिखायथिष्यक्रि॥सनक
चिलनकसूयययक्रन:नीर्य्यग्ध्यनीनयमनाकनयक्र॥
पयक्रानकदाविदचित्रतिलप्यक्र॥यत्रयत्रउस्मन्यूपय
यक्र:गत्रगत्र:जानीजानीजानी।गज्ञातिस्मनारवनि॥ॐ नमा
रगवन:त्र्यतिमिनायूह्लानसविनिश्चित:गजानाजा:गथा:

गणायां स्वंन सं म्यक्संबुद्धा ॥ न यथा ॥ पूंन्य रमहाबून्य : त्रय
त्रिमिण पूंन्य स्थानसं लानाचिण ॥ ॐ सर्ववसस्थान यत्रि शुद्ध : धर्म्म
ग्रं ण : गगनसमभ्रमण : स्वलावुविशुद्ध : महानययत्रिवान स्वाहा ॥ १२ २३
॥ १ज्ञाय दं मयत्रिमिणास्य भें ॥ सिरिवि व्यक्तिः सिरवाय चिव्यक्तिः
णनचउत्राभिणि धर्म्मस्कन्धसहस्राणि : सिखायिणात्रि हवक्ति ॥

ॐ नमो भगवते त्र्यत्रिमिणायूः स्थानसं विनिश्चिण : गजागाजाय
: णथा गणायोः ऽर्हस्न सम्यक्संबुद्धाय : नयथा ॥ ॐ पूंन्य रमहापूंन्य : त्र :
यत्रिमिण : पूंन्य : स्थानसंलानायचिण ॥ ॐ सर्ववसस्थान यनिशुद्धः धर्म्म
ण : गगनसमभ्रमण : स्वलावविशुद्ध : महानययत्रिवान स्वाहा ॥ १ ॥
यः दं मयत्रिमिणास्य भें सिरिवि व्यक्तिः णनचउत्राभिणि धर्म्म

वज्रिकाः सहस्राणि कानाडि यिगानिः अक्षिक्षि यिकानि लवकि॥ ॐ
नमो भगवते। अपरिमितायुर्ज्ञानसुविनिश्चितेजोराजाय॥ तथागता
श्रँ यार्हते सम्यक्संबुद्धाय॥ तद्यथा॥ ॐ पुण्ये महापुण्ये अपरिमितपुण्ये २४
ज्ञानसंभारोपचिते॥ ॐ सर्वसंस्कारपरिशुद्धे धर्मते गगनसमुद्ग
तेः स्वभावविशुद्धे महानयपरिवारे स्वाहा॥ १० ॥ य इदं अपरि

मितायुः सूत्रं लिखि स्यति; लिखापयिष्यति। तस्य यत्रानं तर्यो
ति कर्म्मावरनानि यत्रि क्षयं गच्छन्ति॥ ॐ नमो भगवते अपरिमि
तायुर्ज्ञानसुविनिश्चितेजोराजाय। तथागतायार्हते सम्यक्सं
बुद्धाय॥ ॐ पुण्ये महापुण्ये अपरिमितपुण्ये ज्ञानसंभारोपचिते
ॐ सर्वसंस्कारपरिशुद्धे धर्मते गगनसमुद्गतेः स्वभावविशुद्धे महा

नयपत्रिवाग स्वाहा ॥ १ ॥ हृदय हृदं मयपत्रिमिनायुः सूत्रं लिखित्वा क्तिः लि
खाययित्वा क्ति ॥ तस्य न मागानमा नकाचि कानयक्षान नारुसा नाका
ॐ मल्यू नवर्मा नंग्रमितव्या न ॥ न षांमनन मयनबन बमीः वृद्धि कावृद्ध
समूखं दर्मनं दास्यक्ति नवृद्धि सदग्राहिः तसा हस्ताह स्फुण बांह स्फु उपनाम
यक्तिः वृद्धि स्फुग्रा वृद्धि नत्रंः संकामयंक्ति ॥ ॐ नमो भगवतेः अयपत्रिमितायु ॐ १७

ज्ञानसूविनिश्चितः तजानाजायः तथागताय ऽर्हतेः सम्यक् संबुद्धाः तद्यथा ॥
पुंण्य रमहापुंण्य रअयपत्रिमित पुंण्यः ज्ञान संभा रोपचितः ॐ सर्व संस्कार परि
शुद्धधर्मितेः गगगसमुद्गतेः स्वभाव विशुद्धेः महानय परिवार स्वाहाः
॥ २ ॥ हृदय हृदं मयपत्रिमिनायुः सूत्रं लिखित्वा क्तिः लिखाययित्वा क्तिः तस्य च
त्वा नाम कों हानाजानः प्रव्रज ॥ सम नवु द्धिः नकावनमः शुपिंकलि ब्राक्तिः
ॐ नमो भगवतेः अयपत्रिमिनायु ज्ञानसूविनिश्चितः तजानाजाय तथाः

गगायाऽह्निसंम्यक्संबुद्धाय। नद्यथा॥ॐ युंध्यरमहायुंध्यः श्रयत्रिमिग
युंध्यः स्नानसमानाविनः ॐ सर्व्वसत्वानयत्रिमुर्द्धाधर्म्मिनः गगनसमुद्र
२ कः स्वतावविशुद्धः महानययत्रिवानस्वाहा॥ २० ॥यक्षंदमयत्रिः २°
मिगानायू ३सर्व्वसिरिविध्यक्रिः सीखायचिध्यक्रि॥सूखाद्दर्षीसोकध्यो
:श्रमिरस्यःवृद्धकल्पउवययरक्त॥ॐ नमोभगवतः श्रयत्रिमिगायुः स्नान

सर्व्वविनिश्चितः गजानाजायः नथागतायाऽर्ह्निःसंम्यक्संबुद्धाय॥तद्य
था॥ॐ युंध्यरमहायुंध्यः श्रयत्रिमिनायुः स्नानसमानाविनयत्रिः
नः ॐ युंध्य सर्व्वसत्वानयत्रिशुद्धाःधर्म्मिनः गगनसमुद्रकोः स्वतावः
विशुद्धः महानययत्रस्वाहा॥ २१ ॥यस्मिंपृथिवीमण्डलेत्रयदक्ष
ंदमयत्रिमिगायुः सर्व्वसिरिविध्यक्रि।सिखायचिध्यक्रि॥सयधि

वीप्रदने:वेस्यहूगावह्यनीचम्यतविष्ठाकि:कि र्येह्यअनिगमाना
ह्यगवक्रिदक्षनाकर्डपूढनियगिष्यगि:इनू र्क्लिनायासंम्यक्सँवु
द्धमसंतात्यकु॥ॐनमा रगवते:अपनिमिनायु:ज्ञानसुविनिश्चित १०
तेजोराजाया:तथागतायार्हतेसंम्यक्सँवुद्धाय॥तद्यथा॥ॐ पुंन्यरम:
हापूंन्य:अपरिमित:पूंन्यज्ञानंसंभानोपचिता॥सर्वसंस्कारतप

रिशुर्द्ध:धर्मते:गगनसमुद्गते:स्वभावविशुर्द्ध:महानय
परिवारेस्वाहा॥ २२ तद्य:मैदमपरिमितायूरसूत्रंलिखि
ष्यति:लिखापयिष्यति:तस्यक्षीणायुनकदाचिदक्षिप्रणितस्य:
नमोऽ नमोभगवते:अपरिमितायुर्ज्ञानसुविनिश्चिततेजो:
राजाया:तथागताया:ऽर्हतेसंम्यक्संबुद्धायतद्यथा॥पुंन्येमहापु

॰पमहापुन्यरअयनिमिगायूःज्ञानसंतानायविनयतेउं सर्वसक्रा
नयनिशुर्द्धेःधर्मतेःगगनसमूगतेःस्वभावविशुर्द्धेःमहानय
ॐ यनिवानस्वाहा॥ २३ ॥य ॐ दमयनिमिगायू४सवंननना १८
ऊधर्म्मपर्य्यायंःमूदिश्येःत्रकमचिकाम्वायचंःदानसयितिलन
पिसामस्न्यत्रःञ्रातसत्रस्ययून्धस्कन्धस्यसमाहसको कृगन

यिउ॥ ॐ नमोभगवतेःअयनिमिगायूर्ज्ञानसुविनिश्चिताःते
जोनाजायःतथागतायांर्हतेसंम्यकंबूद्धाय॥तचथा॥पूंन्यरमहा
पूंन्यरअयनितमितःपूंन्यज्ञानसंतानायविनतेउं सर्व्वसस्कान
पत्रीशुर्द्धाःधर्म्मतेःगगनसमूद्गतेःस्वभावविशुर्द्धेःमहानयपः
निवानसस्वाहा॥ २४ ॥य धाविपम्बिमिरिखिविम्बरन्वक्रकूः

श्री
कुछन्द कनकमूनि काश्यप शाक्यमूनि: प्रभृति जिनां: तथागतानां सम्य
क्संबुद्धानां: सप्तरत्नमयी पूजा॰ कृतायां॰ तस्य पूंन्यस्कन्धं गण
यितुं: न शक्यपरिमितायू॰ सूत्र पूंन्यस्कन्धस्य प्रमाणं शक्यं गणयितुं: १२
ॐ नमो भगवते ऽपरिमितायु: ज्ञानसुविनिश्चित तेजोराजा:
जाय: तथागताय: अर्हते सम्यक्संबुद्धाय ॐ पूंन्य पूंन्य महापूंन्य अ
परिमित: पुन्य: ज्ञानसंभारोपचिता॥ ॐ सर्वसंस्कार परिशुद्ध

धर्मते गगन समुद्गते स्वभाव विशुद्धे: महानय: परिवा:
रे स्वाहा॥ २७ ॥ य इदमपरिमितायु: सूत्रं लिखिष्यति लि
खापयिष्यति॥ सत्कृत्य पूजयिष्यति तेन दशदिक्षु बुद्ध:
क्षेत्रेषु सर्वतथागता: वंदिता: पूजिता: भविष्यंति॥ ॐ नमो भ
गवते ऽपरिमितायु: ज्ञानसुविनिश्चित तेजोराजाय: तथा

श्रं गगनायार्हितकसंम्यक्संबुद्धाय ॥ तद्यथा ॥ पुंन्यरत्नमहापुंन्यः त्रयनिमी
तपुंन्यः ज्ञानसंभारा चित ॥ ॐ सर्वसंस्कारपरिशुद्धः धर्मा गगनस
मुद्गतः स्वभावविशुद्धा महानयपरिवारस्वाहा ॥ १८ ॥ दान २०
वसः नसमंतगतबुद्धाः दानवताधिगमानतसिंहः दानवतास्य
वन्धुतायगिसाद्धः कारुनीकसंस्थयुत्रयविमर्क ॥ १ ॥ शीलव:

सनसमन्तगतः बुद्धः शीलवताधिगमानतसिंह ॥ शीलवतास्य:
वन्धुताजेसाद्धः कारुणिकनेस्थयं नवत्र सत्वा भार्ग ॥ २ ॥ क्षान्ति
वसनकृसर्वसमगतबुद्धा ॥ क्षान्तिवताधिगमानतसिंह ॥ क्षान्तिव
सम्यक्कुसागिसद्धः कारुणिकनेपूंदयनमसागं ॥ विर्यवस
नसमगतबुद्धः विर्यवताधिगमानतसिंहः विर्यावसम्यस

ष्टनाथि मद्धकात्रनिकसेस्यपं:स्पतन्मस्तागं:॥ ध्यानवसनसम
गनवृद्धा:॥ ध्यानवसाधिगमानतसिद्ध: ध्यानवलास्वचक्रष्ट
३ लायनिसाद्ध:कात्रनकसेन्यपंस्पतन्मस्तागं॥ प्रज्ञावसनसम २१
गनिवृद्धा॥ प्रज्ञावसाधिमानतसिद्ध:॥ प्रज्ञावसस्वचष्टलायनि
मद्ध:कात्रनिकत्रिस्यपुं:स्पतन्मस्तार्कं॥ जता॥ ॐ नमो मान्म

वक्त:न्नूवन्मि नाय: ज्ञानसविनिश्चित: गङ्गानाजाय॥ तथागता:
या ऽहतिसम्यक्षं. वृद्धायन॥ तद्यथा॥ ॐ पुंन्पर महापूता रन्नूव
नित:॥ पुंन्पर ज्ञानसंतानायचित॥ ॐ मर्बसस्कार परिशुद्धा:॥ म
म्यक्:गगनसमुद्गत: मतावविशुद्धा: महानयपरिवासम
हाश्वा॥ ० ॥ हृद्द मवाबहुगवा ज्ञानम नाय:प्रिरुव मावः मर्वा

वकियवर्ष्रुदगवमानुथाःसन्•जनूउन्धंगंस्वुर्वे ग्वसाःका
ल्गबवगोःलाखिनःमस्वर्वनन्ध्रनिनि॥ज्ञार्य्यज्रवनिमिग
श्रें नामधानगीमलायानस्त्रेसमाफ्छ॥ ० ॥यधर्म्मारुउत्र २२
लावाःरुउगवांकायानिनाथव्रवंवादिमलाथ्रमहंछ॥ ० ॥
जुस॥संमत् ८४१मिग्राउानकार्छनयाःन्रस्याया॥पूवुन

उनजुप॥श्रवुमानजाग॥वृथायवा॥नछसिंदनासिगगस
विनाति॥मीनसासिंतन्धमासि॥ ० ॥थरवूदूसिथयकार
ल॥न्डुरा॥लिरिविक॥यलनकवहिःकाधुयाःवर्जीवार्य्यन
श्रीमार्यिन्धुसिंःउन्रवालाइन॥यलःनायालिमियाकिन
लधिकथंलग॥•॥कामिवन्वग्रःउउमान॥सदाशिव

हाइयाण थ्यपूस्तक थ्वास्यं विया इन्त॥ थ्व पूस्तकयात न्ह सा।संपूं
र्णै।महामंगल इयमा।थ्व चा थयाडा रू लं।छु नक्षा नसंप
१३ लिथ्विन ३ इयमा।श्री ३ भगवान नेहात मां।सूद्दि लि
नयमानश्चा याद धू।पूस्तक दं न्वा।गाद्दि क्षा।रवित्ररविनमया
१३ उद्दि शुध्वं वमम सध्वं वा।मम दारवनक्ष्विया।शुर्लमगलेनवह

[illegible]

आशा सफूकुथि
ASHA ARCHIVES
1.209